[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

[illegible]

५ [illegible]

७ [illegible]

३ [illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

कटिघण्टिंसमस्कुलगात्रा ॥ १० ॥ सद्धलशिम्बयसूत्र
गागू भाक्षिसिद्धभविकाशि कटिविकाशेवैवसू
र्भूतंसदृषसविस ॥ ११ ॥ विमलतमपरमतेर
वेरपाण्डुस्तुतिकगसूत्रमपि स्वैतेत्रमापितेवि
प॰ सुविकङ्कभाकटिलगसेत्रा ॥ १२ ॥ सिवसशक्तिम
श्री॰ लसिवतुभीस्तुगविसूत्रमयीसतसूससाभा सक्ती
७

सिद्धान्त ... [illegible]

नं पद्मासनं विकसितत्रतदेवसतभयादि ७२ पद्मंच
स्तुत्वा सुदृढं पद्मसनं भक्तेश्च । सेवी भगवानसक्तिः ।
भूत्वा वर्णं सिद्धमुद्रा ७४ भगवान्पद्मिनीरूवमाः ।
देवेमलिनः पुष्पभवतसदेवादि कलकलानियादि
लक्ष्मी गाविष्णुं वसेनभगवन्तुः ७७ सपुत्रैवाकि
स्त्रिसेवेसभेवभवानुनैवएनामि भगवानभक्तिदं

५१४५८

कस्मैकथकथमस्यास्तरस्मिन्नभवत्या ॥२ कथक
भिवक्तुलकर्ण्य विविविधं छित्रमन्ठितिमृ ठतात्त
रुद्रविशुद्धिं भिवभानोत्माप्येगत ॥३ भ्रापस्तुः
पभैजभावं विस्मयभक्तलप्तनाठिभान्तास्य भृङ्गाति
रघात्तुः कुरुणं वद्धिमवैजक्तुतिक्रमसः ॥४
सैरङ्गणविरभना भ्रूर्लं मद्गुलीद्वियाणिमवाञ्छे

𑆮𑆱𑇀𑆑𑆳𑆬𑆴𑆥𑆢𑇀𑆩𑆥𑆠𑇀𑆫𑆥𑆑𑆁𑆑𑆢𑇀𑆩𑆴𑆪𑆳𑆬𑆴𑆥𑆤𑆂 𑇑

𑆥𑆒𑆁𑆥𑆳𑆑𑆼𑆮𑆴𑆰𑆪𑆂𑆱𑆑𑆳𑆂𑆱𑆮𑆴𑆑𑆓𑆮𑆬𑆴𑆠𑆼𑆪𑆂

𑆫 𑆃𑆑𑇀𑆫𑆥𑆑𑆁𑆆𑆑𑆳𑆂𑆱𑆢𑆤𑇀𑆪𑆼𑆩𑆢𑆩𑆓𑆤𑆴𑆂

𑇑𑇐 𑆥𑆑𑆁𑆩𑆤𑆮𑆩𑆑𑆬𑆽𑆮𑆴𑆰𑆪𑆱𑇀𑆩𑆑𑆳𑆠𑆥𑆑𑇀𑆫𑆑

𑆃𑆩𑆳 𑆱𑆼𑆠𑆴𑆤𑆂𑆥𑆮𑆤𑆱𑆴𑆬𑆂𑆱𑆬𑆴𑆬𑆁𑆩𑆢

𑆱𑆴𑆩 𑇑𑇑 𑆠𑆰𑆮𑆠𑆬𑆑𑆴𑆑𑆩𑆮𑆠𑆼𑆥𑆤

(9)

त्रिप्रचक्रःभगः षड्वीपद्दत्रेयंमेतत्तंमेदचव

त ११ पञ्चभवरं भलङ्कन्दप्रह्लंभायामिकस्त्र

कंकुलभा गर्केविगूदक्तुपंक्तेमहयवेखुित्रेहृ

हृ १२ सह्लत्रिभिरयेगामेकमपिसंसचवभा

प॰ हृवभा गूकुगूदकानावेमिहृुवसह्रेत १३

भा॰ समवाल्रितमक्कुमिकागुरुपाषुहृयवेक्तुभम

४

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

11

𑆩𑆴𑆱𑆳𑆓𑇀𑆓𑆠𑇀𑆫𑆩𑆱𑆥𑆴𑆮𑆴𑆪𑆩𑆓𑆬𑆳𑆱𑇀𑆠𑆮𑆠𑆴 𑇑𑇗 𑆓𑆠

𑆠𑆱𑇀𑆠𑆷𑆑𑇀𑆠𑆁𑆪𑆱𑇀𑆠𑆮𑆼𑆯𑇀𑆮𑆱𑇀𑆠𑆷𑆑𑆳𑆩𑆨𑆳𑆓𑆠𑆪𑆳 𑆯𑇀𑆫𑆷𑆠𑇀𑆮𑆠𑆴

𑆓𑆴𑆫𑇀𑆘𑆼𑆯𑇀𑆮𑆥𑆴𑆜𑆮𑆠𑆸𑆠𑆘𑇀𑆚𑆜𑆴𑆨𑆳𑆤𑆼𑆪𑆨𑆳 𑇓𑇐 𑆠𑆴𑆩𑆴𑆫

𑇕𑇐 𑆱𑆥𑆴𑆠𑆴𑆩𑆴𑆫𑆩𑆴𑆱𑆁𑆓𑆱𑇀𑆪𑆼𑆥𑆫𑆴𑆨𑆑𑆳𑆤𑆪𑆁𑆱𑇀𑆜𑆼 𑇘𑇐 𑆪

𑆩𑆳 𑆱𑆳𑆘𑇀𑆚𑆮𑆥𑆴𑆱𑆼𑆑𑆱𑇀𑆠𑆷𑆥𑆱𑆮𑆳𑆘𑇀𑆚𑆨𑆳𑆤𑆴𑆮𑆸𑆨𑆳 𑇓𑇐

𑇑 𑆱𑆼𑆑𑆱𑇀𑆠𑆷𑆮𑆴𑆨𑆘𑇀𑆚𑆤𑆥𑆵𑆯𑇀𑆬𑆤𑆤𑆜𑇂𑆥𑆷𑆥𑆯𑇀𑆫𑆼𑆪𑆓𑆼𑆤 𑆯𑇀𑆫

𑆮𑆸𑆯𑆴𑆴

𑆘𑇀𑆚𑆳𑆤𑆁𑆮𑆼𑆣𑆶𑆪𑆠𑆼𑆩𑆴𑆠𑇀𑆫𑆁𑆱𑆬𑆾𑆤𑆱𑆬𑆑𑆳𑆕𑆮 𑇓𑇗 𑆱𑆫𑇀𑆮𑆘𑇀𑆚
𑆮𑆴𑆜𑆮𑆜𑆨𑆤𑆪𑆾𑆓𑆳𑆤𑆤𑇀𑆢𑆣𑆶𑆪𑆾𑆮𑆴𑆯𑇀𑆮𑆘𑇀𑆚𑆳𑆤𑆨𑆳 𑆜𑆕𑆴𑆜𑆶
𑆨𑆼𑆢𑇀𑆪𑆩𑆴𑆠𑇀𑆫𑆁𑆲𑇀𑆫𑆵𑆕𑇀𑆑𑆸𑆠𑆼𑆠𑆴𑆥𑆫𑆩𑆯𑆴𑆮𑆂 𑇓𑇓 𑆱𑆴𑆣𑇀𑆣𑆶
𑆑𑇀𑆰𑆴𑆠𑆴𑆩𑆁𑆑𑆳𑆫𑆍𑆰𑆷𑆫𑇀𑆣𑇀𑆮𑆼𑆨𑆰𑆨𑆥𑆴𑆠𑆯𑇀𑆖𑆴𑆤𑆳 𑆜𑆠𑆴
𑆠𑆩𑆵𑆪𑆴𑆥𑆨𑆳𑆢𑇀𑆫𑆴𑆰𑆳𑆥𑆴𑆠𑆼𑆫𑆑𑆳𑆜𑆠𑆴 𑇓𑇙 𑆍𑆰𑆳𑆱𑇀𑆠𑇀𑆫𑆴
𑆱𑇀𑆮𑆜𑆳𑆰𑇀𑆜𑆨𑆱𑆾𑆬𑆂𑆑𑆶𑆫𑆶𑆱𑆨𑆑𑆳𑆤𑆶𑆘𑇀𑆚𑆳 𑆱𑆫𑇀𑆮𑆂𑆱𑆫𑇀𑆮

𑆮𑆲𑆶𑆬𑇀𑆬𑆤𑆣𑇀𑆪𑆤𑆲𑇀𑆮𑆠𑇀𑆠𑆈𑆂𑆥𑆫𑆁𑆉𑆢𑇀𑆨𑆳 𑇓𑇑 𑆬𑆬𑆛
𑆫𑆥𑇀𑆫𑆨𑆫𑇀𑆬𑆾𑆑𑆴𑆢𑇀𑆓𑆬𑆴𑆤𑆵𑆑𑇀𑆠𑇀𑆫𑆴𑆪𑆠𑇀𑆠𑆼𑆪𑆑𑇀𑆰𑆤𑇀𑆠𑆓𑆓𑆫𑆈𑆬𑆨𑆳
𑆈𑆱𑇀𑆠𑇀𑆮𑆑𑇀𑆰𑆪𑆳𑆮𑆴𑆤𑆝𑆴𑆜𑆴𑆫𑆥𑆫𑆩𑆨𑇀𑆫𑆶𑆂𑆥𑆫𑆂𑆥𑇀𑆫𑆑𑆳𑆯𑆂
𑆥𑆁 𑇓𑇒 𑆱𑇀𑆑𑆨𑇀𑆫𑆴𑆢𑇀𑆣𑆍𑆓𑆓𑆠𑆼𑇅𑆬𑆨𑆳𑆥𑇀𑆫𑆳𑆥𑇀𑆠𑆼𑆜𑆮𑆠𑇀𑆫𑆴𑆤
𑆨𑆳𑆁 𑆮𑆳𑆠𑆴 𑆨𑆬𑆴𑆤𑆳𑆠𑆴𑆈𑆱𑇀𑆫𑆶𑆩𑆠𑇀𑆠𑆼𑆬𑆵𑆮𑆂𑆨𑇀𑆫𑆳𑆥𑆱𑇀𑆫𑆂𑆥𑆜𑆼𑆩
𑇑 𑆱𑇀𑆪𑆂 𑇓𑇑 𑆩𑆳𑆠𑇀𑆠𑆼𑆩𑆠𑇀𑆠𑇁𑆮𑆳𑆥𑇀𑆪𑆁𑆲𑇀𑆫𑆶𑆨𑇀𑆫𑆶𑆲𑆨𑇀𑆫𑆶𑆮𑆴𑆨𑆼𑆤𑆮

𑆠𑆴𑆓𑇀𑆫𑆲𑆂 𑆇𑆠𑇀𑆠𑆶𑆓𑆳𑆠𑇀𑆩𑆩𑆠𑆴𑆨𑆓𑆮𑆳𑆤𑇀 𑆣𑆤𑆂 𑆥𑆫𑆩𑆳𑆠𑇀𑆩𑆠𑆂
𑆩𑆠𑆰𑆳 𑇓𑇓 𑆪𑆩𑆤𑆳𑆤𑇀𑆤𑆶𑆤𑆴𑆫𑆶𑆠𑇀𑆥𑆳𑆮𑆨𑆩𑆤𑆁𑆇𑆠𑇀𑆠𑆶𑆓𑆤𑆴
𑆫𑆘𑆛 𑆯𑆶𑆢𑇀𑆣𑆛𑆤𑆳𑆤𑇀𑆤𑆶𑆥𑆁𑆲𑆸𑆠𑇀𑆫𑆴𑆁𑆮𑆴𑆩𑆬𑆪𑆳𑆠𑆴𑆥𑆫𑆩𑆩𑆴
𑆮𑆂 𑇓𑇔 𑇁𑆓𑇀𑆤𑆁𑆮𑆴𑆢𑇀𑆫𑆶𑆩𑆱𑆶𑆓𑆬𑆑𑆩𑆥𑇀𑆫𑆬𑆮𑆴𑆰𑇀𑆜𑆶𑆩𑆤𑆼𑆤
𑆠𑆴𑆤𑆳𑆂
𑆇𑆘𑆩𑆶 𑆑𑆶𑆲𑆳𑆠𑇀𑆫𑆫𑆑𑆬𑆤𑆳𑆤𑇀𑆱𑆲𑆇𑆥𑆫𑆪𑆾𑆓𑆴𑆤𑆼𑆨𑆮𑆠𑆴
𑆂 𑆥𑆸𑆡𑆴𑆮𑆵𑆨𑆷𑆘𑆳𑆠𑆴𑆩𑆪𑆳 𑆲𑆸𑆠𑇀𑆪𑆩𑆴𑆩𑆁𑆮𑆲𑆱𑇀𑆮 𑇆 𑇁𑆥

𑆠𑆴𑆠𑆩𑆳𑆁 𑆱𑆤𑇀𑆤𑆻𑆠𑆜𑆮𑆤𑆓𑆬𑇅𑆱𑇀𑆠𑆮𑆠𑆴𑆢𑆴𑆩𑆱𑇀𑆩𑆫𑇀𑆥𑆠𑆴
𑆩𑆼𑆰𑆩𑆳𑆁 𑇅𑇐 𑇅𑆩𑆤𑆫𑆘𑇀𑆪𑆬𑆑𑆑𑆼𑆁𑇅𑆜𑆼𑆱𑇀𑆠𑆴𑆓𑆼𑆤𑆱
𑆱𑇀𑆠𑆼𑆪𑆰𑆢𑆼𑆩 𑆠𑆱𑇀𑆫𑆼𑆱𑇀𑆠𑆱𑇀𑆠𑆓𑆼𑇅𑆩𑆱𑇀𑆩𑆫𑇀𑆩𑆖𑆩𑆜𑆠𑆴
𑇅𑇗 𑆠𑆱𑇀𑆫𑆶𑆑𑆶𑆥𑆁𑆱𑇀𑆠𑆢𑆶𑆁𑆩𑆠𑇀𑆠𑇅𑆩𑆜𑆼𑆱𑇀𑆢𑆑𑆁𑆩𑆩𑆁𑆩𑆑𑆬 𑆩
𑆥𑇆 𑆱𑆩𑆠𑆁𑆩𑆠𑆁𑆩𑆘𑇀𑆚𑆼𑇅𑆮𑆴𑆱𑇀𑆫𑆶𑆱𑇀𑆠𑆴𑆜𑆱𑇀𑆠𑆶𑆥𑆳𑆪𑆳𑆩𑆳𑆁 𑇅𑇓
𑆩𑆳𑇆 𑆱𑇀𑆠𑆶𑆁𑆑𑆴𑆤𑆴𑆱𑇀𑆠𑆢𑆠𑆴𑇅𑆩𑆁𑆥𑆱𑇀𑆠𑆢𑆠𑆴𑆩𑆜𑆱𑇀𑆠𑆶𑆥𑆼
𑆈𑇆

16

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

17

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

ण्त्रागभङ्कं स्विश्रनफभैवगमयाणभि १०

ङ्कंङ्क्षैउविकल्पैगालिउधूविलक्षुभैफंगीभयाभा

भलिलेभलिलंश्रीगश्रीगभिवधूक्रंशिलयीश्र

गा। १० ङ्कंउक्षुभप्रफेठवनयाणसिवभयक्षुभफि

याउ कःमैकःकैभैफःभचंधूक्रवलैकयाउः

१७ कफ्रठलंसुठभसुठंभिश्राङ्कैनभङ्कभाबैव

𑆮𑆴𑆰𑆩𑆼𑆢𑆴𑆨𑆁𑆑𑆩𑆼𑆰𑆱𑇀𑆠𑆶𑆰𑇀𑆑𑆫𑆪𑆼𑆓𑆥𑇀𑆫𑆠𑆰𑇀𑆑𑆫𑆰𑇀𑆛𑆼𑆮 𑇕𑇗
𑆬𑆾𑆑𑆲𑆮𑆘𑆫𑆘𑆠𑆁𑆪𑆕𑆘𑆳𑆮𑆴𑆲𑇀𑆫𑆨𑆪𑆩𑆠𑆨𑇀𑆫𑆜𑆂
𑆝𑆼𑆪𑆳𑆯𑆴𑆟𑆢𑇀𑆮𑆨𑆢𑇀𑆫𑆶𑆥𑆢𑇀𑆩𑆥𑆢𑇀𑆩𑆤𑆬𑆫𑆲𑆶𑆂 𑇕𑇘
𑇕𑆂 𑆯𑆱𑇀𑆛𑇀𑆫𑆑𑆬𑆤𑆴𑆩𑆴𑆠𑆁𑆥𑆢𑇀𑆩𑆥𑆢𑇀𑆩𑆲𑆑𑆁𑆠𑆑𑆢𑇀𑆩𑆥𑆴 𑆱𑆴
𑇕𑇘𑆂 𑆫𑆨𑆑𑇀𑆰𑆴𑆠𑆨𑆴𑆮𑆢𑇀𑆫𑆬𑆁𑆫𑆲𑆠𑆴𑆮𑆴𑆰𑇀𑆛𑆫𑆩𑆵𑆨𑆴𑆮𑆩𑆠𑆳𑇅
𑇐𑆂 𑇕𑇙 𑆰𑇀𑆛𑆫𑆨𑆶𑆰𑆴𑆘𑆠𑆨𑆥𑆴𑆫𑆜𑆬𑆳𑆪𑆠𑆠𑆼𑆨𑇀𑆫𑆟𑆢𑇀𑆮𑆑

𑆯𑇀𑆫𑆵 [illegible]

[illegible] 𑇅 [illegible]

[illegible] 𑇅 𑆅𑆠𑆴 [illegible] 𑇅

[illegible] 𑇅 [illegible]

[illegible] 𑇆

𑆯𑇀𑆫𑆵 [illegible] 𑇅 [illegible]

[illegible] 𑇅 [illegible]

𑆤𑆩𑆾 𑇆

ॐ स्वस्ति ॥ श्रीगुरवे नमः ॥ श्रीगणेशा-
य नमः ॥ [illegible]
[illegible]
[illegible] ॥ [illegible]
[illegible]
[illegible]
[illegible]

[illegible] ॥ १

[illegible]

स्थानस्थं सर्वतत्त्वोपरि विमलतमं परम
ऽव्यक्तरूपं तत्त्वादुत्तीर्णमपि सर्वोत्तम
वित्तैर्विलग्नं त्रिलोकाङ्गमेतत् ॥ १२
शिवशक्तिभ्यां शिवतामीशुविष्णुमहेश
ततस्समाभ्यां सर्वीर्यं ब्रह्मणोत्व
नमयाति ॥ १३ पर्यङ्कस्थं सर्व
३
पातालं भद्रमस्य देवी भगवाशक्तिः स्वरूप

॥ १५ ॥

26

[illegible]

२४

प्रमाथिनः

इन्द्रिय एथं गुरूहि विषयः प्रज्ञः खविकणावलिते
यः सुतो उक्त्वपत्रकं उत्तमः मनसोभदि
रभेगतः ३ उपडवडजुलकम्शिकमाव
गतेभ्यनाति प्रवक्रः मनः यस्त्रीपदत्तेयंमे
उत्तंमेदनवेन ११ पदभावरंमलेडन
प्रज्ञो भाषाधिकत्वकं ज्ञुलभा रहुविमुद
हुपंकेमहदयचेत्थिते हृद्ध ११ यच्छति

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

शीघ्रमनित्रषापितेत्र्वातंकृति ३३ ए
सृष्टिसंचेनष्टप्रभूलः प्रकसभेदष्टते
प्रकृः सुत्रवकानुनयानद्वतः यतंत्वप
३४ एलेणप्रमात्मकिह्लिनीक्लियतद
घनगगनतलंमा उदूनयाविद्भिकिय
रमाप्तः पः प्रकमः ३५ एकष्मिद्धए
गगनेरूलम्भहाप्रुकवत्रिनङ्गावि भलिनाति

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

५° [illegible]

६° [illegible]

७ [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

40

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

41

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

43

𑆑𑇀𑆫𑆵𑆝𑆁

𑆯𑇀𑆫𑆶𑆠𑆩𑆖𑆑𑇀𑆫𑆶𑆝𑇀𑆓𑆳 𑇑𑇓 𑆘𑆪𑆱𑆼𑆥𑆩𑆠𑆩𑆘𑆱𑆷𑆢𑆷

𑆥𑆷𑆬𑇀𑆩 𑆱𑇀𑆡𑆤𑆠𑆴

𑆥𑆴𑆘𑇀𑆘𑆤𑆼𑆠𑆷𑆑𑇀𑆫𑆴𑆪𑆳𑆠𑆬𑆑𑆳𑆬𑆴 𑆥𑆫𑆩𑆳𑆘𑇀𑆘𑆮𑆴𑆘𑇀𑆘

𑆥𑆶𑆱𑇀𑆠𑆵 𑆩𑆬𑆪𑆪𑆾𑇅

𑆱 𑆪𑆼𑆤𑇀𑆤𑆪𑆥𑆵𑇅𑆩𑆳𑆯𑇀𑆫𑆶𑆠𑆴𑆮𑆴𑆩𑆬𑆳𑇅 𑇑𑇗 𑆩𑆱𑆤𑆸

𑆥 𑆑𑆼𑆩𑆱𑆮𑆮𑆴𑆣𑆳𑆱𑆤𑆪𑆬𑆼𑆟𑆼𑆩𑆢𑆣𑆳𑆮𑆬𑇀𑆬𑆵

𑆮𑆳𑆑𑆴𑆮𑆴𑆩𑆳𑆫𑆾𑆢𑆴 𑆱𑆶𑆠𑇀𑆪𑆶𑆁𑇅

𑆥 𑆯𑆵𑆁𑆯𑇀𑆫𑆼𑆫𑆮𑆣𑆑𑇀𑆫𑆼𑆬𑆤𑆶𑆠𑆮𑆮𑆴𑆩𑆫𑆱𑆮𑆳𑆱𑆩𑆳𑆠𑆴𑇅 𑇑𑇐

𑆩 𑆩𑆱𑆤𑆸𑆥𑆑𑇀𑆫𑆶𑆠𑆴𑆫𑆼𑆮𑆁𑆮𑆤𑇅𑆥𑆾𑆟𑆮𑆳𑆠𑆴𑆮𑆴𑆟𑆼𑆱𑆁

𑇐𑇗 𑆩𑆢𑆤𑆳 𑆮𑆑𑇀𑆫𑆼𑆝𑇀𑆝𑆶𑆮𑆴𑆫𑆼𑆟𑆼𑆯𑇀𑆫𑆼𑆫𑆑𑆳𑆁𑆩𑆤𑆱𑆶𑆝𑆁𑆤𑆳 𑆥𑆴𑆘𑇀𑆘𑆪𑆾𑆫

𑆩𑆾𑆁𑆮𑆑𑇀𑆫𑆳𑆯𑆵𑆠𑆴𑆥𑆳𑆫𑆩𑆳 𑆝𑆸𑆪𑆳𑆝𑇀𑆟𑆼𑆯𑇅 ‖ | 𑆩𑆱𑆴𑆑𑆴𑆮𑆤𑆼 𑆑𑆥𑆁𑆩 𑆯𑇀𑆫𑆶𑆠𑆩𑆳𑆮𑆴𑆬𑆵𑆤𑆴𑆪𑆁

44

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

कक्षितं

ठक्कुरा 29 श्रापितमाणिक्यदितमिशुंभवाङ्कुरं

विद्रुतचारुभा विकपमपरभावतं येव

त्रिभतच्मयेठवति 30 श्रीजस्वपमगन्देव

रक्षभातिरधिपरित लव्हेदूभा स्कूरभम

कलभजः केवलं यन्तिदतसेकः 31 प

पॱ भॱ इठयश्रीजगभेव विरयायस्वपम भमन्तरिपर

रर गतिः पठ्ठपठकलङ्कमकणाठवतकितर 32

योगिनः

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

||10|| [illegible]

[illegible]

[illegible] ||11|| [illegible]

[illegible]

[illegible] ||12|| + [illegible]

[illegible] + ||13||

[illegible] [illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

53

[illegible] ०३ इति श्रीम[illegible]
[illegible]
[illegible] ॥ ॥
[illegible]
[illegible]
शुभंभ
वतु॥

54

ॐ नमो गुरवे ॥ ॐ नमः शिवाय ॥

ॐ अस्य श्रीभगवद्गीतामालामन्त्रस्य भगवान् वेदव्यास ऋ

षिः अनुष्टुप्छन्दः श्रीकृष्णः परमात्मा देवता अशोच्या

न्वशोचस्त्वं प्रज्ञावादांश्च भाषसे इति बीजं सर्वधर्मान्परि

त्यज्य मामेकं शरणं व्रज इति शक्तिः अहं त्वा सर्वपापेभ्यो

पु॰ मोक्षयिष्यामि मा शुचः ॥ ध्यानम् ॥ पार्थाय प्रति

सं॰ बोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुरा

०३

57

[illegible]

[illegible]

[illegible]

[illegible]

पु॰ [illegible] पल्लवैः, श्रीमत्[illegible], [illegible]

सं॰ [illegible] श्री[illegible]

१७ [illegible] अथ श्री

𑆬𑆴𑆠𑆮𑆴𑆮𑆴𑆣𑆮𑆴𑆰𑆪𑆱𑇀𑆪𑆩𑆤𑇀𑆠𑇀𑆫𑆰𑆴𑆠𑆳𑆁𑆑𑆸𑆠𑆴𑆑𑆳𑆑𑆴𑆠
𑆱𑆴𑆮𑆩𑆳𑆂 𑇆 𑆓𑆵𑆠𑆳𑆂𑆱𑇀𑆮𑆪𑆁𑆘𑇀𑆚𑆴𑆠𑆴𑆠𑇀𑆠𑆶𑆬𑆽𑆖𑇀𑆖𑆶𑆥𑆠𑆼𑆖𑆴𑆪
𑆱𑇀𑆪𑆳𑆱𑇀𑆪𑆳𑆮𑆠𑆵𑆘𑇀𑆚𑆴𑆠𑆴𑆱𑇀𑆩𑆸𑆢𑇀𑆫𑆷𑆰𑆴𑆠𑆽𑆱𑇀𑆩𑆳𑆠𑇀𑆫𑆽𑆂𑇅𑆩𑆳𑆨𑆷𑆠𑇀𑆩𑆽
𑆩𑆤𑇀𑆠𑇀𑆫𑆮𑆴𑆢𑆴𑆠𑆁𑆘𑇀𑆚𑆴𑆠𑆴𑆥𑆬𑆩𑆼𑆬𑆴𑆩𑆳𑆬𑆳𑆘𑇀𑆚𑆴𑆠𑆁𑆠𑆶𑆮𑆴𑆪
𑆪𑆼𑆮𑆴𑆣𑆴𑆨𑆼𑆪𑆬𑆳𑆪𑆳𑆩𑆾 𑇆 𑆠𑆱𑇀𑆩𑆶𑆪𑆁𑆩𑆳𑆠𑇀𑆫𑆶𑆱𑇀𑆩𑆨𑆷𑆪𑆼𑆓𑆳
𑆘𑆴𑆤𑆼𑆤𑆳𑆘𑇀𑆚𑆶𑆫𑆁𑆮𑆴𑆤𑆼𑆩𑆪𑆴𑆠𑆩𑆴𑆑𑇀𑆰𑆩𑆂𑇅𑆠𑆱𑇀𑆩𑆢𑇀𑆫𑆮𑆁𑆠
𑆲𑆠𑆮𑆱𑇀𑆠𑆶𑆂𑆱𑆶𑆑𑇀𑆰𑆶𑆩𑆱𑆽𑆂𑆥𑆷𑆫𑆼𑆤𑆩𑆱𑇀𑆠𑆷𑆩𑆪𑆁𑆤𑆩𑆤𑆳𑆪𑆑𑆿
𑆮𑆴𑆢𑇀𑆪𑆪𑇅

59

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

60

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

𑆥𑆱𑆶𑆫𑆼𑆁 𑆠𑆶𑆜𑆳𑆤𑆴, 𑆥𑆳𑆱𑆶𑆤𑆩𑆱𑆼𑆢𑆳, 𑆑𑆶𑆬𑆪𑆠
𑆖𑆮𑆠𑆵𑆠𑆳𑆮𑆠𑆳𑇅 𑆪𑆼𑆤𑆠𑆴𑇂 𑆱𑆠𑆤𑆠𑆼𑆖 𑆥𑆮𑆠𑆬
𑆮𑆱𑆳𑆁𑆱𑆩𑆱𑆴𑆠𑇀𑆫𑆶 𑆥𑆑𑇀𑆑𑆶 𑆥𑆶𑆤𑆳𑆖𑆳, 𑆑𑆳𑆴𑆑𑆶𑆩
𑆓𑆴𑆱𑆶𑆠𑆤𑆢𑆴𑆱𑆩𑆱𑆴𑆠𑇀𑆫𑆳 𑆱𑆴𑆥𑇀𑆫𑆼𑆓𑆴𑆖𑆴𑆥𑆑𑇂, 𑆪𑆱𑇀𑆪
𑇕𑇂 𑆱𑆵𑆓𑆳𑆬𑆮𑆳𑆤𑇀𑆠𑆶𑆮𑆢𑆴𑆤𑆢𑆤𑆮𑆴𑆢𑆾𑆤𑆴𑆱𑆪𑆾𑆮𑆴𑆱𑆶𑆠𑆼
𑆱𑆁 𑆖𑆾𑆓𑆬𑆠𑆼𑆱𑇀𑆠𑆁𑆱𑆑𑇀𑆫𑆳𑆢𑆑𑇀𑆫𑆶𑆥𑆮𑆥𑆢𑇀𑆫𑆓𑆬𑆱𑇀𑆫𑆶𑆓𑆤𑆾𑇂
𑇑𑇓 𑆠𑆤𑆳𑇂𑇅 𑆱𑆾𑆥𑆴𑆱𑇀𑆫𑆮𑆵𑆢𑆱𑆮𑆠𑆳𑆢𑆖𑆳𑆁𑆑𑇀𑆫𑆶𑆱𑆼𑇂𑆱

66

𑆥𑆢𑇀𑆩𑆪𑆘𑇀𑆚𑆬𑆁𑆖 𑆥𑆳𑆠𑇀𑆫𑆩𑆳 𑆥𑇀𑆫𑆩𑆳𑆠𑇀𑆫𑆑𑆁𑆥𑆬𑇀𑆬𑆮𑆩𑇀
𑆥𑆼𑆑𑆴𑆂 𑆯𑇀𑆫𑆵𑆩𑆠𑇀𑆱𑆹𑆫𑆴𑆂 𑆱𑆩𑇀𑆥𑇀𑆫𑆠𑆴𑆲𑆩𑆱𑇀𑆩𑆸𑆂 𑇅 𑆇𑆠𑇀𑆠𑆩
𑆩𑆥𑆴𑆠𑆠𑇀𑆑𑆬𑆶𑆲𑆂 𑆱𑆁𑆥𑇀𑆫𑆠𑆴𑆥𑆫𑆩𑆥𑆱𑆩𑆤𑆴𑆣𑆶𑆁𑆩
𑆱𑆶𑆂 𑇅 𑆪𑆤𑇀𑆤𑆩 𑇅 𑆮𑆴𑆮𑆑𑇀𑆑𑆼 𑆤𑆽𑆮𑆤𑆴 𑆬𑆴𑆓𑇀𑆓𑆑𑆬𑇀𑆥𑆁𑆩𑆼𑆢𑆨𑆴𑆮𑆼
𑆬𑆴𑆠𑆩𑆳 𑆯𑇀𑆫𑆵𑆑𑆵𑆠𑇀𑆫𑆴𑆮𑆓𑇀𑆓𑆩𑆼𑆮𑆯𑇀𑆫𑆮𑆽𑆥𑆯𑇀𑆫𑆮𑆽𑆩𑆪𑆂𑆠𑆶𑆂 𑇅
𑆤𑆽𑆥𑆯𑇀𑆫𑆴 𑇅 𑆯𑆶𑆂 𑆥𑆥𑆩𑆼𑆬𑇀𑆫𑆣𑆩𑆳𑆩𑆑𑆢𑆩𑆣𑆩𑆱𑆁𑆮
𑆠𑆶𑆥𑇀𑆠𑆨𑆴𑆮𑆽𑆩𑆢𑆩𑆼𑆢𑆯𑇀𑆫𑆮𑆴𑆮𑆴𑆑𑇀𑆑𑆩𑆑𑆩𑆳𑆲𑆷𑆬𑆳𑆮

सम्प्रक्रमि, अङ्गणः समन्तं संविलोक्य, उत्त
रं पीठं तं सङ्घयपीडितां न्यासङ्कितः प
ल्लवितेन कुसुमेन गन्ध, श्रीमानुग्रजाति सङ्घयज्ञय
न्तिगमः कर्म्मयमेति सम्प्रल्पितेन ह्य पक्ष्मः
पु॰ सङ्घसत्यप्रथय स्वप्रहते देवरलङ्घते, तस्य
सं॰ सगम्भः सम्पाकभिक्षः सूर्यद्वतिनिधृते ॥ पुन
७२ वरं, ततः प्रविशति कर्म्मगतिश्च, कर्मः सहे
यम्

69

𑆥𑆷॰ 𑆓𑇀𑆫𑆁॰ 𑇗𑇑

𑆓𑆠𑆴𑆂𑇅 𑆱𑆶𑆢𑆫𑇀𑆯𑆤, 𑆓𑆶𑆫𑆶𑆂 𑆑𑆂𑇅 𑆥𑆢𑇀𑆩𑆤𑆳𑆨𑆩𑆲𑆳𑆫𑆳𑆘𑆩𑆑
𑆩𑆼𑆫𑆶𑆯𑇀𑆫𑆶𑆠𑆴𑆥𑆑𑇀𑆰𑆂, 𑆮𑆴𑆮𑆼𑆑𑆇𑆠𑇀𑆠𑆫𑆷𑆥𑆳𑆪𑆳𑆩𑆴 𑆑𑆳𑆩𑆂𑇅
𑆯𑇀𑆫𑆴𑆪𑆽𑆘𑆳𑆠𑆱𑆶𑆮𑆼𑆯𑆁𑆱𑆶𑆯𑇀𑆫𑆵𑆯𑇀𑆫𑆶𑆠𑆮𑆖𑆬𑆠𑆁𑆮𑆴𑆮𑆼𑆑𑆱𑇀𑆠𑆶𑆥𑆩
𑆢𑆷𑆫𑆨𑆳, 𑆱𑆶𑆥𑆴𑆪𑆳𑆩𑆴 𑆮𑆴𑆯𑆴𑆰𑇀𑆛𑆂 𑆩𑆫𑆩𑆤𑆁𑆮𑆳𑆠𑆶𑆩
𑆩𑆩𑆪𑆁𑆩𑆩𑆫𑆳𑆩𑆶𑆫𑆁𑆠𑆮𑆳𑆥𑆴, 𑆩𑆩𑆫𑆳𑆓𑆩𑆳𑆪𑆴𑆬𑆁𑆮𑆫𑆼
𑆤𑆫𑆳𑆑𑆶𑆩𑆴𑆩𑆠𑆴𑆬𑆑𑇀𑆰𑆶𑆟𑆠𑆴𑆩𑆑𑇀𑆫𑆠𑆶𑆩𑆼𑆠𑆴, 𑆇𑆢𑆳𑆲𑆴𑇅
𑆩𑆶𑆢𑆬𑆷𑆪𑆳𑆪𑆯𑆂 𑆩𑆳𑆥𑆠𑆴𑆮𑆑𑆶𑆩𑆢𑆷𑆯𑆫𑆪𑆁𑆩𑆷𑆬

𑆤𑆳𑆔𑆴𑆫𑆶𑆪𑆳𑆩𑆵𑆱𑆜𑆬𑇀𑆠𑆓𑆶𑆫𑆾𑆫𑆴𑆢𑇀𑆣𑆫𑆫𑆬𑆳𑆩𑆳 𑆠𑆠𑆴
𑆨𑆷𑆪𑆂𑆑𑆽𑆮𑆬𑆥𑆢𑆩𑆥𑆣𑆾𑆑𑆷𑆢𑆠𑆩𑆪𑆳𑆱𑆷𑆩𑆼𑆩𑆠𑇀𑆮𑆳
𑆓𑆤𑆁𑆑𑆠𑆮𑆘𑆶𑆮𑆤𑆽𑆑𑇀𑆰𑆣𑆿𑆮𑆴𑆰𑇀𑆟𑆶, 𑆓𑆿𑆂, 𑆯𑇀𑆫𑆢𑆪
𑆲𑆶𑆥𑆮𑆩𑆾𑆠𑇀𑆠𑆳 𑆩𑆤𑆩𑆤𑆪𑆼𑆩𑆁𑆥𑆠𑆂𑆱𑆳𑆑𑇀𑆰𑆴𑆠𑆮𑆾𑆢𑆶
𑆠𑆴𑆂 𑆪𑆼𑆠𑇀𑆩𑆪𑆩𑆤𑆴𑆪𑆩𑆨𑆷𑆣𑆳𑆥𑆳𑆑𑆩𑆤𑆶𑆩𑆤𑆫𑆬𑆂
𑆱𑆷𑆪𑆠𑇀𑆫𑆼, 𑆑𑆩𑆂, 𑆥𑇀𑆫𑆴𑆪𑆼, 𑆪𑆳𑆤𑆼𑆠𑇀𑆫𑆷𑆬𑆾𑆮𑆴𑆮𑆼𑆑𑆷𑆰𑆫
𑆬𑆮𑆾𑆠𑆪𑆩𑆳𑆱𑆵𑆤𑆑𑇀𑆰𑆶𑆮𑆩𑆤𑆶𑆤𑆢𑆱𑆶𑆩𑆴𑆠𑆳𑆥𑆾𑆠𑆴𑆪𑆠

७१

सम्प्रति गतिप्रकृत्या वृत्तगौरवविध्यादि प्रवृत्ते, उ
पाधि, यद्विं भक्तेर्वक्ते पश्चशक्र मध्यात्मये सम
लोकश्चपरतः क्षेमी मत्स्येयपरिपूर्णः, यमति
यस्य मनप्र ॐ यस्य मञ्जग प्रपरपरौ ॐ समस्त
यत्तुविचित्रकर्तृक मित्रुमाद्यद्व सीधक्रु समयद्र
नागर, वृधिम, श्रियार्वेर्धं नत्वः तेर्वे तेम
श्लोके मगारवकृते, यतः, मन्तुविलैकर्तृकम

पू॰ मं॰ ७२

विलासपत्रिकासकौलिपत्रिभ्यः, स्वर्ग˜सपि
कामिनीनामलमिन्दसमैविकारय, विमेघ
तुङ्गेतेसमसमानसज्जन्दमसकुलेकाम्रितिमस्तु
मिवल्लकेण्डियेणुसानानगपतिसहि˜सप
द्मेवस्मृयिश्चते, गतिः, उद्धरस्तुतेसया, म
स्मकंसमसमविवेकसुन्दुतीनांमैकसहुतिफ
नामितिस्फुसः, उः श्रियैकिसमुते स्फुसहुते

73

ष्ठान मिति, नचलनकारवाप्सकभाविश्वः । उ
घादि, संक्रुतः पूर्वमभिदिस्त्रुग्रमङ्गक्ष्यस्यंम
नडमिविसूर्तपुत्रलः । देलेतंमकलमिसंविस
ज्रक्ष्यत्रेनावैलनितमिमंत्रुलस्वयंनः । उपूपू
५: चाविनिचतीत्रिपद्मपत्रे, उयोः पूचत्तुयहुत्तंम
अं: नमेदपूपानधेकंत्रूलभा निचहुंस्सिवितीयंज
३१ लंविवेकपूपानमिति, गतिः, सुदधडयत्तेवभा

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

समं स्त्रैत्रलयितत्वमसूतः, रतिः, समतं प्रियं,
हृदयस्य किमिदं प्रियं विद्धि यतोऽत्तो गन्तुमा
त्मनः प्रियः कोऽपि मानितः, कामः, प्रिये मनुव
किं त्वविमुक्तं गीलमा, रतिः, हृदयस्तत्त्रिंशे
५ ङ्गहते, कामः, प्रिये तवती स्त्रीतिरश्चीनापिति न
पं त्वत्तनलं कृत्वा पापीयमामन्त्रितयते, रतिः,
७३ मत्यमा हृदयस्य कीदृशं तत्ता, कामः, प्रिये

रठेतुहुमा जतसंजमासाभतुसेतत्ती, भत्रि
किलैखकिंवमत्ती, भरमकंतुलैकलगाड़ि
कल्दभूफविसुजमगाव्हा भीमवद्दूत्रुतउति,
ग्रतिः मनयमा गविकाकप्रमम कंतुलेग
वमीतिविपतेमेहुमवमा, कमः, बियेकिंव
मत्तीभतुमेततो, गतिः, भपउयागक्काप्राकिं
कतुवमा, कमः, बिंवभन्निकिलधूएपतुं

सरस्वती, ॐ मः सङ्कसध्क्लिं तह्वगन्धिनीसायै
त्रितत्त्वायै सावसद्युष्टपिसनः पूर्णयतस्थं लै
कान्त्रस्तत्त्वसात्मा उसनसेवगाद्रिश्चुतेप्यरसे
विष्णुतेकत्वायययात्तत्त्वुससदेसरस्त्रगानी
पू: सर्वं सम्तुंत्तलसा, रतिः सनसेक्सयसोत्र
सं: दयपुपविद्याद्धिवदतितद्वासानिकुसि, कामः,
३७ सनसासापसन्क्रुयस्वगतसा सद्रकृमेद्धिसन्

𑆫𑆬𑆠𑆫𑆠𑆓𑆠𑆬𑆱𑇀𑆪𑆱𑆼𑆟𑆪𑆼𑆑𑇀𑆑𑆶𑆩𑆴 𑆠𑇀𑆫𑆳𑆁 𑆨𑆶𑆤𑆪𑆶𑆓
𑆑𑆫𑆨𑆑𑇀𑆰𑆨𑆑𑆓𑆂, 𑆖𑆟𑆵𑆓𑇀𑆫𑆲𑆳𑆂 𑆩𑆴𑆬𑆶𑆑𑇀𑆰 𑆬𑆴𑆮𑆬
𑆪𑆱𑆼𑆮𑆬𑇀𑆬𑆴 𑆩𑆴𑆠𑆂 𑆥𑆟𑆵 𑆩𑆷 𑆩𑆼𑆢𑆁 𑆬𑆤𑆪𑆠𑆴𑆱𑆁
𑆩𑆵𑆬𑆪𑆠𑆴𑆱, 𑆩𑆶𑆑𑆳𑆱𑆁, 𑆩𑆠𑇀𑆟𑆁 𑆥𑆴𑆮𑇀𑆫𑆶𑆃, 𑆥𑇀𑆫𑆴𑆪𑆼𑆤
𑆑𑆼𑆠𑆲𑆩𑆳 𑆯𑆶𑆝 𑆨𑆬𑆵𑆮𑆑𑇀𑆫𑆶 𑆘𑆼𑆠 𑆮𑆴𑆯𑇀𑆫𑆼 𑆢𑆠𑆴𑆂, 𑆓
𑆠𑆴𑆂, 𑆠𑇀𑆫𑆢 𑆥𑆢 𑆯𑆧 𑆑𑆴𑆁𑆠 𑆱𑇀𑆪𑆳𑆓𑆑𑆳 𑆱𑇀𑆪𑆳𑆠𑆢 𑆠𑆴 𑆓𑆑𑇀𑆰
𑆑𑆁𑆥𑆶𑆠𑆴𑆥𑆑𑆳𑆃𑆁 𑆩𑆑𑇀𑆰𑆠𑆳, 𑆑𑆳𑆩𑆂, 𑆑𑆳𑆩𑆟𑆳 𑆩𑆳𑆥

77

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

पू॰ सं॰ ३॰

𑆪𑆁𑆄𑆤𑆄𑆤𑆴𑆤𑆼𑆠𑆮𑆴𑆟𑇀𑆜𑆾 𑆤𑆑𑆠𑇀𑆫𑆳𑆩𑆴𑆤𑆜𑆾𑆠𑇀𑆫𑆳𑆩𑆴𑆩𑆠𑇀𑆫𑆳
𑆮𑆳𑆩𑆴𑆩𑆮𑆱𑇀𑆪 𑇦 𑆥𑆑𑆱𑇀𑆫𑆳𑆩𑆴𑆩𑆮𑆱𑇀𑆪𑆩𑆠𑇀𑆫𑆳𑆥𑆾𑆪
𑆩𑆴𑆩𑆮𑆱𑇀𑆪 𑆱𑆪𑆩𑆮𑆴𑆢𑆼𑆠𑆼𑆫𑆱𑇀𑆫𑆳𑆁𑆥𑆱𑆩𑆵𑆠𑆫
𑆩𑇅 𑇡 𑆱𑆁𑆑𑆠𑇀𑆫𑆾𑆠𑆼𑆁𑆄𑆤𑆩𑆤𑆤𑆱𑇀𑆫𑆳𑆑𑆴𑆁𑆱𑆴𑆠𑆂
𑆤𑆁𑆑𑆠𑇀𑆫𑆾𑆠𑆴𑆫𑆴𑆮𑆴𑆱𑆵𑆄𑆁𑆢𑆵𑆫𑆭𑆳𑆥𑆵𑆜𑆮 𑇢𑇅
𑆑𑆴𑆮𑆴𑆱𑆫𑆾𑆟𑆤𑆩𑆴𑆠𑆴𑆱𑆴𑆱𑇀𑆫𑆪𑆮𑆴𑆑𑆴𑆤 𑆥𑆱𑇀𑆫𑆳
𑆱𑆤𑆓𑆼𑆤𑆁𑆮𑆵𑆠𑆩𑆑𑆂𑆭𑆳𑆥𑆵𑆜𑆮 𑇣 𑆪𑆢𑆮𑆴𑆱𑇀𑆫𑆳𑆩𑆴
𑆱𑆩𑆳𑆥𑇀𑆠𑆂𑆥𑆁

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

८०

त्क प्रिभूः नभूमेन मिगंरक्ष्मिभिधरक रधिन्ह्र

नायकृन्ते विलसभाषीठव ०४ निःमह्नवि

ध्रुवियभिक्ंस्वधक्मेनिगञ्जनः स्वयमेवग्निसुर

रुःअभाधिमत्रिभुक्ति ०५ रुयाप्त्युभिसंवि

स्वरूविपक्षयशाऽतः सुमूवमुमुक्षुपमुंभागामः

क्षामुमित्तुतभा ०६ निरपेक्षोनिश्चिकानिरु

रः मीडल्नामयः स्वगाधरक्षितिगर्भोरुवमिक्ष

[illegible] ८४

इवामन: ३१ आकारमयं विश्वं निराकारं तु

निष्कलम्। [illegible] ३३

यद्दैवा [illegible] पत्तः पवित्र [illegible] तद्दैवा [illegible]

[illegible] पवित्रः पर [illegible] ३७ [illegible]

हेमव [illegible] निर्विग [illegible]

[illegible] ४० [illegible]

[illegible] ३३

गुरुः पारः ॥ तत्वज्ञमन्त्रकलाभेदैर्विविधविग्रहः ॥ ०

यथोक्तमनयास्मिन्केन्द्रमन्त्रपालनात् ॥ सुतमम [margin: मन्त्रसूत्रं]

पालनच्छेद्यमन्त्रसंकलितम् ॥ मसृणीकृतमिमं [margin: कुलानि कलिका मनसि ...]

विश्वं परिपूर्णमयाप्ता ऊर्ध्वं मलापह [margin: ... मलत्रय ...]

परमात्मविलोकनं ॥ यथान्तर्यन्तरिन्द्रियम्

दुःखेनस्वरूपः ॥ शुद्धेन्दुतत्त्वं विश्वमात्म

विविधमा ॥ ॥ उक्तमार्गेण वस्त्वेवपदेयमयि

सापितः श्रुत्वा तच्चाद्देवेशं तस्याश्चिह्नं विसापित
मृष्टमुं
मा ५ पश्चिवेज्ञारमेज्ञुं धत्तेनाहाधैवसङ्ग
तथापिविज्ञं मयिज्ञुं धंमयाहाधं निरस्तमा ६
श्रुत्वातान्नगमुदितश्रुत्वानावृत्तभेत गल्लुद्ग
पु॰ नामितिद्विततमुनामृमेतवादि ७ धूकसेम
व॰ निर्गुधृनातिजि जेमृतंतः यसापृकमतवि
७ मृष्टमि
३२ स्वंतत्त्वं तमापवादि ३ पदिविकल्पितं विश्व
मष्टमुं

मङ्गलाच्छायितमत कध्रंस्तुत्रो ठलीगच्छुवाग्निभ्र
दकेरयघ ७ मतोविनिजतंविस्त्रंमन्दोवलयभ
हृति मामित्रभ्रे ललीवीमि:कनकेकलकंयघ ८
अनेकरूपंनमोमक्तंविनामयभ्रुनाभ्रुभ सक्राभि
सुभ्रुभदत्तं लगत्राभेधितिभ्रुतः ९ अनेकरूपं
नमोमक्तमकेरूपंमेरूवाग्नधि कामित्रगतनागा
त्रणाभ्रुविस्त्रभवाक्तितः १० अनेकरूपंनमोमक्तं

चतुष्कल्पनायाः   विमर्शयतः

ईदृगम्बुजस्यपाणिः कल्पितेऽभया स्वंविभ्रम
तेनिहंनिविकल्पक्लिप्तेश्रम ०२ यदिमयिस्थि
तं विश्वंवभृतेऽभयेनक्लिप्तेऽभा। नभेवतुभिमेषो
वाहृत्तिःमात्तानिरसुया ०३ भमगीगभिमं
विश्वंनकिञ्चिच्छितितिनिश्चितेऽभा। मुमुमिमस्पृश
मतत्क्लिप्तकल्पनापुन ०४ मर्गींभुजनगकौ
रवेमिलोकयंतथा कल्पनाभाऽभवेत्क्षिभकं

विमर्शयतः तस्य ... ...॥

विधिनिषेधादि ... ...। ... किंम कल्पं ...

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

91

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

94

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

95

[illegible]

[illegible] ॥

स्निग्धतरम मय्यनन्तभक्तेर्भूमिर्विश्वपतेऽद्भुतः
श्रान्तवतेऽनह्मतिनमभामुमद्विभूत ० मय्यन
न्तभक्तेर्भूमिर्लगम्बीसीभूतवतः ऽमेऽवामुमा
याऽनभवामुत्रमद्यातिः ३ मय्यनन्तभक्तेर्भूमि
विश्वंनाभविकल्पना भ्रातिमात्तनिमकामात्तम
वाह्माभ्रितः ३ नाद्भुतवर्धनेतवामुरनत्त
निरुल्लेन ऽहमत्तेमाः माभ्रात्तमेवाह्माभ्रि

[illegible]

ओं ॥ अथ सिद्धान्ते भवनाभिमुखलेपसंलग्नतः ।
अनेन भमकसंवृत्तयोः परिधिकल्पनं ५ उदाहरणं
वृत्तं समपुंसमपुरुकाल्पं । १ ॥ श्रीगुरुनवम
अर्धवृत्तस्य पिण्डं किञ्चिच्छिद्रं सममुखं किञ्चि
द्वृत्तं मध्ये किञ्चित्प्रथमं ० अर्ध
समवृत्तस्य पिण्डं नवच्छिद्रं सममुखं नवछिन्न
मध्ये नवप्रथमं ३ अर्धवृत्तस्य पिण्डं

[illegible]

[illegible]

[illegible]

[illegible] । ३ ॥

[illegible]

[illegible]

[illegible]

99

मतप्युक्त्यायभुग्रयतिसंमतेः ७ पञ्चकृतविक
संभूकृतमाह्वयतेः उक्तं मृतुविमृतेः मृत
पञ्चैठविधृमि ७ वृमनापवसंमाङतिमचा
विभङ्गतः उक्तं गौवमनज्ञागाद्दितिगमयथा
उक्त उ ङहक्षवरेतोनवसंभूकरमा ७
विजयवीरि कमभमर्तंमानतमक्तलमा पञ्च
मधृतयेहृतंमचहनामंकरु ० मप्रवृकुएलवहु

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

𑆬𑆴𑆱𑆓𑆵𑆓𑆬𑆴𑆱𑇀𑆪𑆳𑆥𑆳𑆤𑆴𑆩 𑆱𑆁𑆩𑆠𑇀𑆠𑇀𑆮𑆳𑆣𑆴𑆤𑆩𑆶𑆤𑆴𑆠𑆮

𑆍𑆰𑇀𑆩𑆳𑆤𑆴𑆍𑆰𑇀𑆩𑆳𑆤𑆴 𑇗 𑆱𑇀𑆮𑆬𑆨𑆼𑆠𑆶𑆑𑆨𑆼𑆤𑆱𑇀𑆮𑆘𑆼𑆠𑆼𑆤

𑆣𑆴𑆑𑆩𑇀𑆫𑆶 𑆩𑆲𑆷𑆂𑆱𑆁𑆱𑆳𑆫𑆑𑆫𑇀𑆠𑆷𑆤𑆮𑆴𑆩𑆷𑆠𑇀𑆠𑆩𑆑𑇀𑆠𑆩

𑆤𑆂 𑇑 𑆘𑆠𑆁𑆑𑆠𑆴𑆤𑆍𑆰𑇀𑆩𑆳𑆤𑆴𑆑𑆪𑆼𑆤𑆩𑆤𑆱𑆳𑆓𑆴𑆫

𑆱𑆂𑆥𑆱𑆳𑆪𑆳𑆩𑆱𑆁𑆑𑆩𑆠𑆩𑆠𑇀𑆮𑆳𑆥𑆷𑆥𑆤𑆩𑆶𑆠𑆳𑆱𑆳𑇅 𑇓

𑆠𑆠𑆶𑆣𑆶𑆮𑆑𑆼𑆘𑆾𑆱𑆱𑆱𑆁𑆥𑆶𑆑𑆫𑆳𑇅 𑇑𑇐 𑇆

𑆛𑆮𑆳𑆛𑆮𑆮𑆴𑆑𑆳𑆫𑆱𑇀𑆮𑆱𑇀𑆮𑆛𑆮𑆳𑆩𑆴𑆠𑆴𑆤𑆴𑆱𑇀𑆮𑆪𑆵 𑆤𑆴

𑆛𑆮𑆶𑆛𑆮𑆑𑇀𑆫𑆶𑆥𑆴𑆮𑆴𑆑𑆳𑆫𑆂 𑆩𑆳𑆪𑆳𑆠𑆠𑇀𑆫𑆶𑆱𑆁𑆑𑇀𑆫𑆳 𑆱𑆮𑆫𑆮𑆼𑆑𑇀𑆫𑆳𑆂𑇅

𑆱𑆘𑆳𑆲𑆴𑆠𑆶𑆬𑆩𑆘 𑆑𑆳𑆩𑆩𑆼𑆣𑆶𑆱𑆷𑆤 𑆑𑆢𑆼𑆲𑆘𑆂𑇆

103

विकल्पगतक्लेशः अपि नैव [illegible] मामुति ० संस्तुतः

भवति अम्नत्वं नत्त्वहति निश्चयी स्वतन्त्रलिङ्गभवा

मः मात्तुः क्वाधिनमह्नते ७ अथमः अभ्यसः कल्

मेवाम्मेवेति निश्चयी स्तुः स्थलक्षिये निहं नवाच्छु

तिनमेमेति ७ अथम्तुः पल्लम्भत्तु मेवाम्मेवेति

निश्चयी मेघाम्मकीनिरुयाभः जवन्नधिनलिपु

ते ८ मित्रयाम्यवतेम्तुः पंनात्तुघेदेति निश्चयी

104

उपशीतः श्रीमान्तः भत्तुगलितभ्राजः ५

नाकं स्पृशन्नभिमतैर्यदृभिति निश्चयी केवलं भि

वअधूष्पुनभ्रम [illegible] ७ [illegible]

तुभवभवेति निश्चयी निर्विकल्पः सुमिः मान्तः

पूर्णपूर्णवि निश्चितः ७ नानाभेदभिन्नं विश्वं न

किंचिदस्तीति निश्चयी निराभासः [illegible] नकि

ञ्चिच्छिवमात्रस्थिति ३ [illegible]

[illegible]

106

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

𑆱𑆁𑆪𑆓𑆳𑆪𑆼𑆓𑆮𑆴𑆓𑆢𑆳𑆱𑆢𑆩𑆳𑆩𑆼𑆪𑆔𑆳𑆱𑆳𑆥𑆩𑆳। ३ 𑆱𑆷 [illegible]

𑆥𑆼𑆠𑆤𑆳𑆱𑆶𑆩𑆼𑆢𑆤𑆴𑆂 𑆩𑆴𑆱𑆴𑆢𑆶𑆮𑆼𑆠𑆤𑆮𑆳 𑆤𑆶𑆩𑆼𑆬𑆳 [illegible]

𑆩𑆼𑆮𑆴𑆢𑆪𑆳𑆱𑆳𑆱𑆢𑆩𑆳𑆩𑆼𑆪𑆔𑆳𑆱𑆳𑆥𑆩𑆳। ४ 𑆱𑆠𑆳

[illegible] 𑆤𑆠𑆼𑆤𑆩𑆴𑆱𑆴𑆲𑆓𑆠𑆮𑆳𑆩𑆪𑆼𑆤𑆤𑆮𑆳 𑆠𑆴𑆱𑆶𑆤𑆱𑆶𑆱𑆁 [illegible]

𑆱𑆶𑆱𑆳𑆱𑆢𑆩𑆳𑆩𑆼𑆪𑆔𑆳𑆱𑆳𑆥𑆩𑆳। ५ 𑆱𑆳𑆥𑆳𑆱𑆴𑆠𑆶𑆥𑆳𑆤𑆴 [illegible]

𑆪𑆁𑆁𑆖𑆮𑆼𑆱𑆳𑆬𑆼𑆑𑆶𑆤𑆴𑆩𑆽𑆂 𑆱𑆶𑆖𑆱𑆶𑆖𑆼𑆮𑆴𑆢𑆪𑆳𑆱𑆳

𑆱𑆢𑆩𑆳𑆩𑆼𑆪𑆔𑆳𑆱𑆳𑆥𑆩𑆳। ६ 𑆢𑆠𑆱𑆳𑆮𑆫𑆼𑆠𑆼𑆫𑆪𑆼𑆩

[illegible]

109

[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible marginal notes]

110

[illegible]

[illegible]

|| 5 ||

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

116

पि नान्यत्प्रकाशमिति ॥ ४ ॥ उपशान्तमिदं नित्यं स्वच्छं स्वस्थं

यदा मनः पश्यति कर्मभेदाद्गुणैर्विभक्तं [illegible] ॥ ५ ॥

विरक्तो विषयेभ्यश्च रागी विषयलोलुपः गुरुभेदा

विलीनभूतं विरक्तो न रागवान् ॥ ६ ॥ [illegible]

वं [illegible] विरक्तः [illegible] वर्तते [illegible] निवि

[illegible] ॥ ७ ॥ [illegible] निवर्तते

[illegible] निवृत्तो [illegible] भवति [illegible]

[illegible] ॥

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] [illegible]

[illegible] [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

कम्पठयनुभक्तजनमनः

वाममुपश्रितभा । स्वविकल्पमतः श्रीमद्भक्तावम

नमयः ॥ १८ श्रायमुः पिनरेनन्दं मम्भक्तुसविप

क्षुम विमद्येवतीयत्रमचस्यममज्जितः ॥ १५ न

किंमानमकनहं नाम्रूठं नयमीनडा नाम्रूठं नेवम

दोठः श्रीमंमरेनडे ॥ १६ नभक्तेविषयस्वेषु

नवाविषयल्लपः स्वमंमक्तमनः निहुपुपुपु

पुधास्नुते ॥ १७ ममापानाममापानफिडफिडवि

122

[illegible]

[illegible]

गान्ताप्रेरितप्रद्धलान्ता। नाडिभवपविष्टगात्रैस्त्रामी
ठवेत्। ३ कदृष्टः यभान्तान्तसुलाम्युक्ताज्ञः ऊ
तः भूसमपीतप्रधानामान्तेप्यमा। ३ ठवेयंठव
नाभेनाकिञ्चिद्गमागतः नामुठवःप्रठवानंठव
स्वं ठववितठविनाभा। ५ नम्रंनमसभक्तेमान्त्वभवान्
वं नःपमभा। निर्विकल्पंनिराधारंनिर्विकारंनिराश्र
०३
५५ नभा। ५ हभेदभाइविस्तेप्रतुपानान्नभाइतः वी

124

३ सेक विराल्लेति निरावर ˉ सामाखयः ८ ममंक
ल्पन संर्स्वसाम्रसत्त्वःसतत्त्वः इति विष्णुयोगेषि
कि सत्स्वशुतिरालवत्। १ शुद्धस्फटिति निर्मितरत — पत्रं मनो
वाठ वेसकल्पिते निष्कुसः किं विष्णनाति किंकृते — कारुण्यं मनस
सकरेति किम्। ३ अयं सेरुसयं नारुसिति यो — निर्गुणमय
शुविकल्पनः सयसाम्भति निर्मितरुङ्कुकुतश्च — सस
योगिनः ७ न विज्ञाधेनसेकागुंनातिरपेनसरु

पविकल्पहे

ॐ नमाध्येनमस्कारः परमपमात्रस्वरूपयोगिने ॥ ० ॥

कृतघ्नः कृतकार्यः कृताज्ञः कृतविवेकिने दुधं

भवगस्ते

लघुभिसंवेदिवद्धृष्टमूर्त्तरूपयोगिने ॥ ०० ॥ भगस्तेते

लालभूत्र

हृदङ्घ्रिमलाहलाहेलनेवने विविकल्पश्वरवश्च

प: नविमेघेस्मिंयोगिने ॥ ०३ ॥ तद्धंकिमुमितैकामि ।

नगः सीवनाद्र सुभवगीत्र

व: नकपिहतप्रियाज्ञत्रा यष्टाशीवनभवदशीवा ।

०७

५५ हरूयोगिने ॥ ०३ ॥ कामेदः कृमवादिसुंकात ।

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

तेपिलेकवत्रा नमभाष्टिंनविद्धेपंनलेपंस्रुमूपसृति
ठवाष्ठवविशीत्रेयपमृधेविवाभचेशठः तेवकिञ्चि
स्तुत्हृष्ठामा ठवात्र हृउेनेलिकृन्दूष्ठापिञवड ७ धवडेवानिव
प: डेवातेवृत्तीगमूडनूनः पठ्यकुउभायाग्रिहृ
व: वत्रिमुडःप्राप्तभा ७ः त्रिवाभचेनिरलषःस्रुम्
०३ वैभजञवञुनः क्रिमुःमंमृणवाउेनयेमुउेस्रफ्प
५० ल्वत्रा ३० पमंभानमुउकापिनदैचनविधापि

128

[annotation: धकृष्मि गदितः मिवड्व]

ऽ धमीत्र लभतानिहं विन्दिते दण्डवणान्ते ३३ ऊर्ध्व

पितृलिङ्गमात्रिकमेवापितऊर्ध्वमिति धृष्टमधृ

[annotation: illegible]

मीगधृमीडलाग्रकुरुगधृतं ३३ धनहस्कृत्वमिति।

[annotation: illegible]

धृकुवतिधृयधक्रुधा धनतस्त्रैवणीगधृतमात्रेन

वभातेन ३२ गुरुं देवेनकमेदंतमयात्रकृष्णि

ण्ण दुतिमित्रुवरीणीयां ऊचवपिकोतिन ३१

धतकृष्णीमकृजनतेनावधतवपिवालिमां णीवधृ

[annotation: illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

दृष्टिं तु भक्तं भूगा[illegible] ॐ निहत्य तु से [illegible] वा पियपत्रि
तु नय्वतेत निद्रिं मितु मिमं कितु निहत्य यति विय
क्षुते १० ऽद्वैयथा [illegible] कलू भमः [illegible] तिभुक्
रु मा [illegible] वा [illegible] तिमं [illegible] सभ [illegible] किपि भूक्व
रा ३४ [illegible] निरं [illegible] वा [illegible] तेइमभो
गीरा: [illegible] तिमभुवद्भूपा [illegible] ड: ३५
[illegible] य [illegible] नायै तिनि [illegible] ति ऽ[illegible]

मितु निरं [illegible] ता ३१

यमाहुर्न्यग्रहोद्भवत्तिनिश्चतः ३२ शुद्धं बुद्धं प्रियं
प्रलं निशुप्राद्विनिरामयं भद्रं तं नमामि सततमह
मपराजितः ३५ नाप्नोति कश्चिन्मैत्रं विमुक्तोह
महाविष्णु शुद्धे विशुद्धं ग्राह्यं मुक्ताभिमुखं विवि
यः ३६ ग्रहणाप्नोति बुद्ध्या यत्र निवृत्तिमिच्छति
प॰ तनिष्ठुं तत्परां गतिं प्राप्य कृतकृत्य परं त्वम् ३७ नि
व॰ रागानन्दं नामप्रतः संमानपरयोः वामे
०३
५३

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

136

[illegible]

स्वप्नमा

आपमात्रे आपं सेते आपमायात्रियाडिम आपंब
त्रिमापं कुकेहबदरेपिमात्रली: पत्र स्वठबाह
मनैवात्रिलैकबहूबदगि॥ मदफ्रस्तबाह्लैहि
गतलोम: अमैठते ९. विवत्रिगपिमस्थठम्
त्रिमपलपत्र मवत्रिगपिलीरेमूविवत्रिचलठ
गिरी १० परिगृदेषवैरागंधायेमठमदस्रुत
टदेविगलितामम्रकारगा: कविरगता ११

मितविकल्प परिहृतात्मा

मधु ४० १०

रगतैरंगु येभ्र
टिभानांत्ररठविहृता

[illegible]

[illegible] १३ [illegible]

[illegible]:

[illegible] १४ [illegible]

[illegible]:

[illegible] १५ [illegible]:

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

140

वंपमृतमृतैः क्रविद्या कामवाविश्रुंकृसेदं कंममेतिव
१२ विरोधाधीविकसल्लिलावदिशणरुढीटद्धि मौरे
रघावृलाघंद्वकतुमाप्रेहतः क्षणत्र १४ मृद्धःमृ
द्वापितृद्वमुवलावहिविमृठंतं विविकल्देवदिहे
द्रठतुविषयलालमः १६ द्वदास्रलितकद्रघेले
कद्रत्पिकसलत्र नाप्रेहवमारकतुवकृमेवर।
किाद्वा ११ कातमःक्षकमैवदंत्कमरकिाद्वा

[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

144

ष्टेः ३० प्रकाश्यः कस्मात्सर्वेनिर्द्वन्द्वकिंचिदंत
रः स्वभावः सर्वत्रवेद्यकेवलोऽमतेजः ३१ निर्म
लः सोऽहं तेजोऽयः सम्यग्भूतकाश्चः अहिंस
दयार्द्रचित्तोत्तरमत्सुमः ३३ सर्वत्र
नष्टचित्तवृत्तिर्नित्यं सत्यं चेतनसुख
तुलनाकेवलरूपतः ३४ सर्वज्ञोऽपि वराङ्घ्रिपरमूर्त
पिनयज्ञतः सर्वज्ञोऽपि परमसूक्ष्मैर्विचारमनास्ते

कर्मेन्द्रियैः कर्मभवनापि

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

रक्षीयत्वेवस्पृशान्वेविस्पृशान्वेनक्रुध्यति नैवेन्द्रियोर
भवत्यतीवनेनाठिरन्द्धति ७७ नयावडिताक
कीलंनागन्दमपमातृणीः यद्यात्वषायत्वत्वमम [निर्विकल्पः]
यकावडितुत्वे ०.. तद्घ्रावक्रेमात्रिमत्वकंन
ब मामुद्रकंयुकन्~मा ७३ सिद्धेत्वचाय ॥
ब दिडडुविह्लवमञ्जेवमाद्यदत्तदयैदानाज नि
॥ नादि०पनमषमल्लिङ्गाःनत्वेमया ० क्षुण्णः

148

[illegible]
[illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

कोह्यियालिङ्गवभरः कस्तत्त्वं कायवेन मं भद्रद्वयेरि
गच्छते १ कस्यां कुं कास्मि विद्रुं कोवशिचिषयं भरः
कस्थिन्निः कविद्रस्य दृङ्गतद्गुमुषभेमतः २ कवि
[illegible]
द्राक्समवाविद्राकान्दकेषं ममकत्व कोवद्गःकम
[illegible]
वभेदः सद्रूपपद्गककूपितः ३ कस्याङ्गु विकम
लियतीवद्युक्विंपित्कूत्व कतद्विदेदकैवल्यं वि
विद्वेयपद्गुमवदः ४ कककद्गुमपवकैत्रशि।

151

𑆒𑆶𑆁𑆪𑆁𑆦𑆓𑆬𑆁 𑆘𑆑 𑆘𑆥𑆴𑆠𑆁𑆛𑆬𑆁𑆮𑆘𑆴𑆂𑆩𑆜𑆮𑆶
𑆩𑆩𑆛 𑇅 𑆘𑆬𑆴𑆑𑆂𑆘𑆤𑆩𑆝𑆮𑆘𑆪𑆽𑆓𑆵𑆲𑆶𑆤𑆮𑆘
𑆮 𑆘𑆮𑆢𑆂𑆘𑆥𑆮𑆩𑆑𑆂𑆱𑆮𑆑𑆾𑆢𑆩𑆝𑆮𑆼
𑆘𑆩𑆴𑆂𑆘𑆱𑆁𑆢𑆫𑆂𑆘𑆩𑆳𑆲𑆁𑆘𑆩𑆳𑆟𑆫𑆩𑆳 𑆘𑆩𑆳
𑆟𑆑𑆂𑆘𑆩𑆴𑆲𑆴𑆮𑆳𑆱𑆮𑆑𑆾𑆢𑆩𑆝𑆪𑆼 𑇑 𑆘𑆥𑆩𑆳𑆝
𑆥𑆩𑆳𑆁𑆮𑆳𑆘𑆥𑆼𑆪𑆁𑆘𑆟𑆥𑆩𑆳 𑆘𑆑𑆴𑆑𑆴𑆘𑆫𑆑𑆴𑆲𑆴
𑆲𑆩𑆮𑆟𑆮𑆴𑆩𑆬𑆨𑆷𑆥𑆼 𑇒 𑆘𑆮𑆴𑆮𑆼𑆑𑆂𑆘𑆽𑆑𑆁𑆓𑆷

𑆮𑆽
𑇑𑇓

ऊरिडिणः ऊप्रत्र ऊदघः ऊविघादिवमव
दविष्णुयधूमे ७ ऊमेषहवदगिवाऊमेधा
प्रमाऊड ऊमगंक्रमवाडःपंविविमद्व
मेमद १० ऊमायाऊममंदगःऊश्रीडिविगडिः
ऊव ऊलीवःऊमऊकृमवडविमलष
मे ११ ऊपवउडिडिवडिवाऊमपडिः ऊम
ठक्रुनमा ऊटप्रविविठगपष्ठमभुप्रममवद १३

[illegible]

155

155

156

𑇄 𑆤𑆩𑆂 𑆱𑆫𑆱𑇀𑆮𑆠𑇀𑆪𑆽 𑇆 𑇄 𑆠𑆠𑇀𑆱𑆠𑇀 𑇆 𑇄 [illegible]

[illegible]

[illegible] 𑇆 𑇆 𑇄 [illegible]

[illegible] 𑇆 [illegible] 𑇆 [illegible]

[illegible] 𑇆 [illegible] 𑇆 [illegible]

[illegible] 𑇆 [illegible] 𑇆 [illegible]

[illegible] 𑇆 [illegible] 𑇆 [illegible] 𑇆

[illegible] 𑇆 [illegible] 𑇆 [illegible]

[illegible] 𑇆 [illegible] 𑇆 [illegible]

[illegible] 𑇆 [illegible] 𑇆 [illegible]

कनकः अभावित्रमापभा ॥ सत्रिभत्रेनेसगीर्वद्धः ॥
क्रुउभत्रेनक्रुउभषषक्रु विसर्गभड्ढूः ॥ सुत्रुविसर्गेस
यास्त्रत्रेसद्धश्रिक्षुः ॥ भजहृसन्त्रभत्रेनान्सद्वी
दन्तठवः ॥ ॥ इति श्रीविधान्यपुस्तकमन्त्रं प्रथम उ
ल्लासः ॥ ॥ श्रिङ्कभत्रुः ॥ धूयत्रुः भापक्रुः ॥ विसर्गस
गीरभङ्गभत्रुरकृश्रुभा ॥ गन्तृश्रिङ्गविकस्मे विश्रिषु
विसर्गश्रुषः ॥ विसर्गअभङ्गनेश्रुण्ठविकोपेसगीश्रिव
वस्त्रु ॥ गुरुकृधान्वः ॥ भाद्रकसत्रुअभ्रुषः ॥ सगी
रंहविः ॥ स्नुनभत्रभा ॥ विसर्गअभङ्गनेउस्त्रुउश्रुषस
ज्ञनभा ॥ ॥ इति श्रीधान्यपुस्तकमन्त्रं द्वितीयोल्लासः ॥ ॥

۱۳

[illegible]

159

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]